ॐ नमः श्रीरत्नवानिताकार्य

२८

2232

ARCHIVES

१७

नीदागामसहितादशागहोंथनफलयमह

[illegible]

स्वस्ति श्रीगिरिराजचक्रचूडामणिनरनारायेत्यादिविविध

[illegible]

ॐ नमः श्रीगुह्यकालिकायै४ ॐ नमः श्रीगुरुभ्यो४ अथ लवस्वधनं४ फुट् अस्त्राय फट्
फ४ फु यहनिंरश्वषनं४ फु नहनिंरुदहनं४ फु वहनिंरप्लावनं४ अथ भयशुद्धि४ ॐ आगोत्व
निर्विमह श्रीगुह्यकालिखिमहतनन्नसिद्धिपर्वदियान४ अथ शीकानलिखवर्ले४ मर्थे हूं
लिखवर्ले४॥ अथ हूं ३धेनुलिंगजानिमुद्रीप्रदर्श४ अथ गीतगुनजावमनं४ हूं अस्तनत्वाय स्वा
हा४ हूं विद्यातत्वाय स्वाहा४ हूं शिवतत्वाय स्वाहा४ हूं ३४ अथ गंदस्तवन्दनं४॥ ॐ ह्रीं महाश्म
शानसिवस्तक्रिमणपतनस्थिलाकमतत्तमानय ॐ ह्रीं नमः स्वाहा४ सिवादिश्रीगुरुभ्यो न

म४ अस्मद्गुरुभ्यो नमः४ परमगुरुभ्यो नमः४ ई इर्मनीयेनमः४ श्रीकरुणापालायनमः४ सत्सन
स्वर्णेनमः४ पंपनमात्मनेनमः४ गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवमहेस्वरः गुरुर्देवपर
ब्रह्मतस्मै श्रीगुरवे नमः४ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मि
लितं येन तस्मै श्रीगुरवे नमः४॥ ॐ ह्रीं पञ्चहूं फट् ४ अथ प्राणायाम४ हूं यहनीं४ हूं न
दनीं४ हूं वहनीं४ १८४॥ अस्य श्रीकालाग्निनिर्वाणश्रीगुह्यकालिमहाविद्यामन्त्रस्य
कालाग्निरुद्रऋषि४ जगतीछन्द४ कालाग्निनिर्वाणश्रीगुह्यकालिदेवता४ हूं विजं

हूं शक्ति४ ह्रूं कीलकं४ कालाग्निनि[र्वा]ण श्रीउग्रकालिमहाविद्यासिद्धान जपे विनियो
ग४॥ ह्रां अंगुष्ठाभ्यां नम४ ह्रीं तर्जनीभ्यां नम४ ह्रूं मध्यमाभ्यां नम४ ह्रैं अनामिकाभ्यां
नम४ ह्रौं कनिष्ठिकाभ्यां नम४ ह्रः करतल करपृष्ठाभ्यां नम४ हूं हृदयाय
नम४ ह्रीं शिरसे स्वाहा४ हूं शिखायै वौषट्४ हूं कवचाय हुं४ ह्रौं नेत्रत्रयाय वौषट्
हूं अस्त्राय फट्४ हूं हूं हूं कालाग्निनिर्वाण श्रीउग्रकालिमहाविद्ये प्रसीद२
मां नक्षर२ हूं न म स्वाहा४ लिंगाजलि हंजलि नमस्कारं४॥ हूं हूं हूं४ काय४ हूं

हूं हूं हूं त हूं४ थीय४ हूं हूं हूं४ हाय४ हूं हूं हूं हूं त हूं४ ध्यानानंगिय४ हूं
लषनय४ हूं अल ४ हूं हूं हूं महाकालप्रमथनि
कालाग्निनिर्वाण श्रीउग्रकालिमहा विद्ये ममनि प्रमथ२ मानक्षर२ हूं नम
स्वाहा४ हाय४ हूं लिनं४ हूं ४कपाल४ हूं ४डाला हात न४ हूं ४खडाला हातो न४
हूं सिद्धि श्म श्मनमहा हूं रात्रमहा विद्ये निविद्य ण म हासिद्धि उग्रक
लिमहाविघ्न पक्ष निक्ष२ मानक्षर२ प्रसीद२ हूं नम स्वाहा४ नरलसन४ हूं हूं हूं म

तांभगानमरात्मावर्ज्जितनियगुपात्तविम्बवनिमत्पालुपालमहादिदाषान्सीदन२का
लाग्निनिर्व्वाणग्रीउग्रकालिममसर्व्वाग्निन्क्षा२ हुं ननस्वाहा४॥ अथभयग्रीनर्जुघवि
य४ अथभयग्रीनिगुलिनेजप४॥ विरतिभा चनात्तमाफ४॥ अथ अस्य मातृकान्या
स४॥ अस्य श्रीमातृकात्तनस्वनिमन्त्रस्यब्रह्मासवि भयग्रीवृन्द४ श्रीमातृकात्तनस्व ति
दवता४ हलांविज्ञानि४ स्वनाकय४ अव्यक्तयकिलर्क४ श्रीमातृकात्तनस्वनिप्रसादन
ममगनीनगुह्यार्थन्यास विनियोगः४ ॐ अं कं खं गं घं ङं ॐ आं अंगुष्ठाभ्यां नमः४ ॐ इं चं छं

ॐ जं झं ञं ॐ ईं तर्जनीभ्यां नमः४ ॐ उं टं ठं डं ढं णं ॐ ऊं मध्यमाभ्यां नमः४ ॐ एं तं थं दं धं नं ॐ
ऐं अनामिकाभ्यां नमः४ ॐ ओं पं फं बं भं मं ॐ औं कनिष्ठिकाभ्यां नमः४ ॐ अं यं रं लं वं शं षं सं हं
ळं ॐ अः करतलकरपृष्ठाभ्यां नमः४ ॐ अं कं खं गं घं ङं ॐ आं हृदयाय नमः४ ॐ इं चं छं ॐ
जं झं ञं ॐ ईं शिरसे स्वाहा४ ॐ उं टं ठं डं ढं णं ॐ ऊं शिखायै वषट्४ ॐ एं तं थं दं धं नं ॐ
ऐं कवचाय हुं४ ॐ ओं पं फं बं भं मं ॐ औं नेत्रत्रयाय वौषट्४ ॐ अं यं रं लं वं शं षं सं हं ळं ॐ
अः अस्त्राय फट्४॥ पंचाशद्वर्ण्णुर्तदेविहितवदनदोःपादयुक्कुक्षिवक्षोदेहांतास्वत्क

पद्मकलित गात्रिकलामिन्द्रखण्डुविदानां शुक्लप्रकुं तावं नाम लिलिखितकना शुक्ल
पद्मसंस्थाम् सख्याकल्पामनुक्तं स्तनजघं तना तानेनिं नानमामिः॥ अ आ इ ई उ
ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः॥ करव ... नथ ... नपर्व तान
यन तव ... हृक्षः॥ अ [illegible] नमः आ [illegible] नमः इ [illegible] नमः ई [illegible] नमः उ [illegible] नमः ऊ [illegible]
नमः ऋ [illegible] नमः ॠ [illegible] नमः ऌ [illegible] नमः ॡ [illegible] नमः ए [illegible] नमः ऐ [illegible] नमः ओ [illegible] नमः
औ [illegible] नमः अं [illegible] नमः अः [illegible] नमः॥ थ्व नं ... नथः॥ [illegible] नमः [illegible] नमः [illegible] नमः [illegible]

नमः [illegible] नमः थ्व नं जडालालातः [illegible] नमः [illegible] नमः [illegible] नमः [illegible] नमः [illegible] नमः थ्व नं ख
डाला लातः॥ [illegible] नमः [illegible] नमः [illegible] नम [illegible] न मः [illegible] नमः [illegible] थ्व नं जडा कु
तिः॥ [illegible] नमः [illegible] नम ः [illegible] नम ः [illegible] न मः [illegible] नमः थ्व नं खडा तु तिः॥
[illegible] न मः [illegible] नमः [illegible] नमः [illegible] नमः [illegible] नमः [illegible] नम [illegible] नमः [illegible] न
मः [illegible] नमः [illegible] न मः [illegible] न मः [illegible] न मः [illegible] न [illegible] [illegible] न म
ः थ्व नं ... ः ... नार्यः॥ [illegible] ३ [illegible] ३ [illegible] ३ः॥

२ अस्य श्रीनिर्वाणश्रीगुह्यकालीश्रीमद्दक्षिणमहामन्त्रस्य पञ्चब्रह्म ऋषिः। अ
ग्र्यकष्टुहनीछन्दः॥ निर्वाणश्रीगुह्यकालि देवता॥ ह्रूं बीजं। ह्रीं शक्तिः। नमः कि
लकं। निर्वाणश्रीगुह्यकालीप्रसादेन सर्वकर्मप्राप्त यविनि योगः॥ । अङ्गुष्ठा
भ्यां नमः। तर्जनीभ्यां नमः। मध्यमाभ्यां नमः। अनामिकाभ्यां नमः। कनिष्ठिकाभ्यां
नमः। करतलकरपृष्ठाभ्यां नमः। सर्वज्ञ शक्तिधाम्ने निर्वाणश्रीगुह्यकाल्यै हृ
दयाय नमः। नित्यतृप्ति शक्तिधाम्ने निर्वाणश्रीगुह्यकाल्यै शिरसे स्वाहा। अ

नादिबोध शक्तिधाम्ने निर्वाणश्रीगुह्यकाल्यै शिखायै वषट्। स्वतन्त्र शक्तिधा
म्ने निर्वाणश्रीगुह्यकाल्यै कवचाय हुं। अलुप्त शक्तिधाम्ने निर्वाणश्रीगुह्यका
ल्यै नेत्रत्रयाय वौषट्। अनन्त शक्तिधाम्ने निर्वाणश्रीगुह्यकाल्यै अस्त्राय फट्।
अथ ध्यान। अथ जाप। अथ स्तोत्र। यागेश्वनि महामाय सर्वमंगलमंगले। सर्व
हत्सी०मध्यस्थे गुह्यकालि नमोस्तु ते। सुनासुनवन्द्य पूजितपवनमध्वनि
सर्वैश्वर्यप्रदमान गुह्यकालि नमोस्तु ते॥१ अथ अर्घ्य नादि सं। तखस्थने। आ

वमन। गणेशादिवंदन। मातृकान्यास। ज्ञानास्थपन। हुं १० ज्ञानाधिय। धेनुलि
ङ्गज्ञानिमुद्रांप्रदर्श्य। ॥२ अस्य श्रीसामनस्य निर्वाणश्रीगुह्यकाल्याः श्रीमन्महाय
ज्ञोपवीतधारणमहामन्त्रस्य परब्रह्म ऋषिः। गायत्री छन्दः। श्रीसामनस्य परब्रह्म
निर्वाणश्रीगुह्यकालि देवता। बीजं। हुं शक्तिः। हुं कीलकं। श्रीसामनस्य श्री
गुह्यकाल्याः श्रीयज्ञोपवीतधारणार्थे दूर्तिकमुद्रा र्थे विनियोगः॥ हुं अंगु
ष्ठाभ्यां नमः। हुं तर्जनीभ्यां नमः। हुं मध्यमाभ्यां नमः। हुं अनामिकाभ्यां नमः।

हुं कनिष्ठिकाभ्यां नमः। हुं करतलकरपृष्ठाभ्यां नमः। हृदयाय नमः। शिर
से स्वाहा। शिखायै वौषट्। कवचाय हुं। नेत्रत्रयाय वौषट्। अस्त्राय फट्।

हुं हुं हुं हुं हुं हुं सामनस्य परब्रह्म निर्वाणश्रीगुह्यकाली २ महाकाली
२ महा मायमहाचन्द्रयोगेश्वरि २ परब्रह्मगज्ञामालिनि २
ब्रह्मगज्ञा लायज्ञोपवीतमालिनि २ विष्णु २ गज्ञालायज्ञोपवीतमाली

नि२ रुद्रगणज्ज्वालायज्ञोपवीनमालिनि२ हृष्टिगणज्ज्वालायज्ञोपवीनमालिनि
२ स्थितिगणज्ज्वालायज्ञोपवीनमालिनि२ संहारगणज्ज्वालायज्ञोपवीनमालिनि२
अनाख्यागणज्ज्वालायज्ञोपवीनमालिनि२ भासागणज्ज्वालायज्ञोपवीनमालिनि२
सिद्धिकाली२ सिद्धिकनालि२ नित्यशुद्धबुद्धमुक्तसत्यपनमानन्दानन्दसामन
स्यपनब्रह्मनिर्वाणगुह्यकालिमन्त्रगणज्ज्वालामालावर्त्तिनमहासामनस्यपन
ब्रह्मनिर्वाणश्रीमन्महायज्ञोपवीनम हं ध्यानयामि प्रसीद२ मीनक्रो२ ममनक्त

ल्तह्रां२ श्रीगुह्यकालि हुँ फट् नमः स्वाहा ४॥ ज्ञानानन्दौ रवाय ४॥ त्मयत्रीन क
अर्घवियज्ञ ४॥ त्मयत्रीनं जपयाय ४॥ रथनर्पनलिखण॥

२ ग। ण त्रादि गुरुवादि प्रानाम॥ अस्य श्री गुह्य गल्यनीमत्रस्य धंन्व त निम
षि ४ त्मयत्री छन्द ४ अस्य श्री नी दवता ४ हुँ बीडं ४ क्रौं लक्ति ४ नमः कील
कं ४ अस्य त स्यु कान्ने विनियोग ४॥ क्रूं अङ्गु ष्ठादि॥ क्रूं हृदयादि॥

पाठमध्यत्री कौन लीबर्ले मध्य ॐ लीघर्ले ॥ अथतर्पनी ॥१॥ श्री गुह्य
कालीतृप्यतु ३४॥ ॐ श्रीगु ॐ ह्य तै न वं तृ प्यतु ३४॥१ ॐ गु
ह्यकाली श्रीगुह्य ॐ तै न वं तृ प्यतु ३४॥१ ॐ आनिम ॐ खा
पियतु हंसमरवमं ॐ तलीतृप्यतु ३४॥ गु ॐ तृप्यतु ॐ प
नमगु तृप्यतु पनम श्रीगु तृप्यतु पनापनं गु तृप्यतु
आत्म तं नात्मपनमात्मानिर्वाण श्री गुह्यकालीतृप्यतु॥

ॐ १ आत्मतत्त्वेन निर्वाण श्री गुह्यकाल्यां प्रज्ञ हामि ॐ नमः स्वाहा
ॐ १ विद्यातत्त्वेन निर्वाण श्री गुह्यकाल्यां प्र ज्ञ हामि
ॐ नमः स्वाहा॥ ॐ १ शिवतत्त्वेन निर्वाण श्री गुह्यका
ल्यां प्र ॐ ज्ञ हामि ॐ नमः स्वाहा॥ ॥

ॐ श्रीगुरुचरणकमलेभ्यो नमः॥ न्यास॥ प्राणायामादी॥ फ्रें अंगुष्ठाभ्यां नमः॥
रक्ष्क्रं तर्जनीभ्यान्नमः॥ हस्क्ष्रीं मध्यमाभ्यान्नमः॥ ह्स्ख्फ्रें अनामिकाभ्यान्नमः॥ ह्सौं कनि
ष्ठिकाभ्यान्नमः॥ फ्रें करतलपृष्ठाभ्यान्नम॥ ॥ एवं हृदयादि॥ ध्यानं॥ नीलाञ्ज
ननिभाकारा द्विभुजा कुलनायिका॥ एकवक्त्रा महादेवी त्रिनेत्रा चन्द्रशेखरी॥ स्थू
लरूपा त्वियं प्रोक्ता वरदाभयहारिणी॥ सूक्ष्मरूपा महेशानी कथयामि तवाधु
ना॥ वह्निपद्मासनायोगी स्थीरकायमहिध्वजत्॥ क्रत्वा खेचादिकं न्यासं स्मृत्वा
श्रीगुरुपादुकां॥ ध्यानं इति॥

निरञ्जनकमलासनाय पा॰ पू॰ ४

शो

१ ष्ट्राँ पापभक्षणाय पादुकां पूजयामि नमः॥ श्रीँ क्रीँ हूँ ह्सौँः पादुकां ६॥ क्राँ क्रीँ क्रूँ क्रैं
क्रौँ क्रः आज्ञाकुसुमाय पादुकां ६॥ ऐँ ५ हक्षः हक्षः हक्षः ह्म्ल्व्र्यूँ सर्वाधिकार
य पादुकां ६॥ फ्रें रक्ष्क्रें हस्क्ष्रें हस्ख्फ्रें ह्सौंः श्रीनिर्वाणस्थैर्य पादुकां ६॥ ऐँ ५
क्ष्म्ल्व्र्यूँ श्रीमहानिर्वाणेश्वरानन्दनाथ क्ष्म्ल्व्र्यूँ क्रौँ श्रीँ परमनिर्वाणेश्वरीमहि
नाय पादुकां ६॥ ह्सौँ पादुकां ६॥ ऐँ ह्सौँ निरञ्जनाय विद्महे निरा

कारायधीमहीतन्नोसुंन्यप्रचोदयात् ॥ श्रीअमुकानन्दनाथदेवोहं पादुकांपूजयामी

नमः ॥ थ्वतेनंवली ॥ ॥ ॥जाप॥ ष्ठ्रूं पापभक्षणायस्वाहा ॥ श्रींक्रींह्रूं

ह्सौंः स्वाहा ॥ ऐं५ हक्षः हक्षः हक्षः ह्स्ख्फ्रौं सर्वाधि कारायः स्वाहा ॥ फ्रें ख्फ्रें हस्फ्रें ह्स्ख्फ्रें

ह्सौंः स्वाहा ॥ क्ष्म्ल्व्र्यूं क्ष्म्ल्व्र्यीं क्रौं श्रौं स्वा ह्स्क्ष्म्ल्व्र्यूं हा ॥ ह्स्ख्फ्रौंः स्वाहा ॥ ॥ ॥

श्रीसिद्धिलक्ष्म्या ॥ ॐ ऐं ॐ ह्रीं श्रीं क्लीं ह्रीं श्रीं हूं हां हौं सौं क्रौं फ्रें ख्फ्रें हस्फ्रें ह्स्ख्फ्रें नमः ॥ फ्रें ख्फ्रें हस्फ्रें

ह्स्ख्फ्रें ह्सौंः ॥ ॐ ॐ ॐ ह्सः स्हौं ॥ ह्स्क्ष्म्ल्व्र्यूं ॥ ह्स्ख्फ्रें ॥ ख्फ्रें ॥ ख्वं ॥ ॥ ॥पश्चिमाम्नायाध्या

नं ॥ ॐ श्वेतपद्मस्थितं शान्तं मे क्ष्म्ल्व्र्यूं कवक्त्रं त्रिलोचनं ॥ हिमकुन्देन्दुसंकाशं शुद्धस्फटि

कनिर्म्मलं ॥ द्विभुजं चाभयं दानं वामोरुत्संगदेवतं ॥ शितवर्णा महादीप्तं किंचित्स्मा

राङ्गवर्णिकां ॥ वराभयकरां दे वीं दीव्यरूपामहोज्वलां ॥ एवं योगेश्वरीं ध्यायेत् सर्व

कामानि साधयेत् ॥ ॥

१थयन्त्रश्रीनिर्वाणश्रीगुह्यकालि
देवतायानिर्वाणयामूलयन्त्र ॥

१थयन्त्रश्रासिद्धिकालिदवताय॥



ॐ नमः सर्व्वसिद्धियोगिनिभ्यो नमः सर्व्वसिद्धिमातृभ्यो नमो नित्योदितानन्दनन्दितायै सकल
कुलचक्रनायिकायै भगवत्यै चण्डकापालिन्यै तद्यथा ॐ ह्रीं हूं हां फ्रें क्ष्रौं क्रौं नमः ॐ परम
हंसिनी निर्व्वाणमार्ग्गदे विषमोपप्लवप्रशमनी सकलदुरितारिष्टक्लेशदलनि सर्व्वापदा
म्भोधितरणि सकलशत्रुप्रमथनी देवी आगच्छ २ हस २ वल्ग २ नररुधिरान्त्रवसाभक्षणि
मम स्वशत्रुमर्द्द २ खाहि २ त्रिशूलेन भिन्दि २ छिन्धि २ खड्गेन ताडय २ क्षेदय २ तावद्यावन्म
मम सकलमनोरथान् साधय २ परमकारुणिके भगवति महाभैरवरूपधारिणि त्रिदश
वरनमिते सकलमन्त्रमातः प्रणतजनवत्सले देवी महाकालि कालनाशनि हूं ३ प्रसीद

मदन्नातुरां कुरु २ सुरासुरकन्यकां ह्रीं श्रीं हूं फट् ३ स्वाहा ॥ इति मालामन्त्रम् ॥ ॥ ॥
ॐ ह्रीं हूं फ्रां फ्रूं फ्रौं नमः स्वाहा ॥ ॥ ॥ ॐ ह्लीं बगलामुखी सर्व्वदुष्टानां वाचं मुखं
पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ॥ ३६ ॥ ह्रीं ॥ १ ॥

[illegible]
2232
ASSAM ARCHIVES



श्री





१श्रीनिर्व्वाणश्रीगुह्यकालिदवतायाध्वयन्त्र॥



१थं श्रानिर्वाणग्रंगुह्यकात्तियायन्त्र॥

१ श्रीत्रिपुरसुन्दा-देवताय श्रीयन्त्र॥



१थयन्त्रु दसव कुण्ग्री गुह्यकालिदवताया